DPN 5529

Title : शिवनामस्तोत्र / ŚIVANĀMA STOTRA

Run. No. 6220 Cat. No. Micro. No.

Subject स्तोत्र Hymn Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 21 X 8·5 Folios 17 Lines (in a page) 6/7

Extant (12-21, 24-30)

Compl. / Incompl. Chapt. / act /

Author / translator Scribe / donor

Date: NS / SS / VS / KS Ruler / place

Script : New. / Dev. / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper / thyasaphu /

Condition : fine / damaged by worms, rats, water /

Beginning, colophon, post-colophon :

0 cm. 5 10 15 20

२९८ शिवनामस्तोत्र

वामध्वजाय गुरवे· ह्रीमन्मायनमोनमः॥ श्यामकाय निविडाय
कदाराय नमो नमः॥ गङ्गाधराय कवच नागनाथाय नमः
। रुक्मप्रियाय महते· चन्द्रीमायय ब्लायनमो नमः॥ पूर्णाय ह
नपतये· सर्वज्ञाय दयालवे॥ धर्म्माय धनदप्राय· गजचर्म्माम्ब
राय च। शालनेत्राय प्रमाणाय· त्रीलोकपतये नमः॥ २७॥ ऊर्ध्वः
नन्तसनील· लोहिताय नमो नमः॥ अन्धकसूदनः कृते· पावना

यवलायच ॥ वैनत्याय त्रिभंगाय · दक्षिणालकनायच । नमस्ते दशभुः
शिरसे जपरूपायते नमः ॥ सहस्रेसचरणायाथ · आगिकल्लोलवासि
ने । सद्योजातायवंद्याय · सर्वदेवमयाय च । अघोराय प्रलाय· १२
भयग्रीवल्लसायच । धर्मकानाय विप्राय · नमो विष्णुप्रियाय च ।
अघोरनायस्तुवंद्याय · त्र्यंबकरूपायते नमः ॥ विद्वल्लमायच क्रोध · वि
विश्वत्रसायनन्दिने ॥ ३० ॥ अधर्मिनाक्रुबलास · इन्द्रहीर्माथः

नायच । अजानंतवपुर्धाय · जगत्त्राणाय ते नमः ॥ नमो ब्रह्मकपाल
कृत पञ्चवक्त्राय रक्षिणे । हविकर्माय विरूपे · पञ्चवक्त्राय
वक्रिणे । नमः पंचाक्षरायाथ · भवनंमंगलायच । भूतवज
न जीवाय · कालकूटविषादिने ॥ सिद्धिमन्त्राय सिद्धाय · सहस्रवद
नाय च । नमः सहस्रहस्ताय · सहस्रनयनाय च ॥ सहस्रमूर्ध्नि
वपुषे · विश्वाय जगताम्पते । काशीनाथाय गोप्त्रे · नमस्ते विश्वमा

क्लिं ॥ हतव सर्व्वजीवानी· पालनायनमा नमः ॥ जगत्संदानकाय
त्रिधावस्थायनमः ॥ त्रकादशात्वरूपाय· नमस्ते वरूमूर्तिया नः
त्रसिंहमहादर्प्पे· घातिनमनरुायच ॥ रुरूपस्थकायनीर्थय· जा
क्रवीजनकाय च· ॥ देवदानवदैत्यानां· शुवर्णनमा नमः ॥ दसिनी १३
जनरुामाय· नमावायूत्वरूपिणे· ॥ नमः खेचरत्वरूपाय· प्रसिद्ध
यनमा नमः ॥ वृषरुध्वजाय· गोष्ठाय· जगत्यक्तुप्रवलिने· ॥ जूना

थायप्रजगाय· विष्णुगर्व्वहनायच ॥ ४० ॥ हरिविधात्कलह· नाश
कायनमा नमः ॥ गदांकहस्तायवढव· गगनायनमा नमः ॥ केव
ल्परूलदात्रने· पद्मायनमा नमः ॥ ह्लनायह्लातगम्याय· घण्ट
रवप्रियायच ॥ पद्मासनायपुष्टाय· निर्व्वाणायनमा नमः ॥ भूः
थानयमुद्र द्राय· कूरूमायनमा नमः ॥ भूतनकायाघिपतय· विः
शालाक्षायनमः ॥ कूवलवन्धवदर्प्पे· सामायरुक्षिने नमः ॥

अमृतांशायसोमाय·रविचन्द्रायधन्विने।।त्रिविक्रमायदक्षाय·वन्दिने
विष्णवायच॥४७॥गिरिशायगिरित्राय·गिरिधिष्ण्यकायते नमः४॥
पार्थिवाजातायहंसगा·पङ्कजपत्राक्षायते नमः४॥हृषीकेशाय विशिष्टाय· १४
बालरूपधरायच।जीवनेशायपूज्याय·पूज्यानांपतयेनमः४॥
रुद्रहर्त्रे दिव्यरूपाय।केनिष्ठायनमोनमः४।मध्यमायविश्वभर्त्रे
मूलायरुक्मांगायच।।आदित्यतापनायाथ·पूज्यलोकायते

नमः॥२

नमः।महाकायकायरुद्राय·वामनायनमोनमः४॥नमस्तेस्थूलरूपाया
य·चतुर्हस्तायमोचिने·।नमोधूर्जटयेतुभ्यंजगदीशायतेनमः
॥५०॥जगन्नाथायमहते· [redacted] लीलाविग्रहकारिणे।अरूपायनम
स्तुभ्यंममनाथायनमोनमः४॥अनन्तायनमस्तुभ्यं·मत्स्यरूपायनमो
नमः४॥लोकाध्यक्षायनमस्तुभ्यं·मनादिनिधनायच॥व्योमकालना
यवधकाय·नमस्तेपद्ममालिने।लघवेस्थूलरूपाय·नमः४परेशु

धारिणे॥ नमः खड्गहस्ताय नागहस्ताय ते नमः॥ वरदाहय
हस्ताय। घण्टहस्ताय ते नमः॥ घस्मराय नमस्तुभ्यं मण्डिता
य नमो नमः॥ शूलिमादिगुणेशाय। पंचवक्त्रमयाय च॥३३॥ १७
पूतातनाय रुद्रायै क्षप्रमथनाय च। पूर्णानन्दमयाय प्राज्ञाय। वि
मूर्त्ताय नमो नमः॥ उदाराय विचित्राय। विचित्रगतये नमः।
वाग्विशुद्धाय चित्ताय। निर्गुणाय नमो नमः॥ प नमोन्त्रायाय ते।

पाय। नमः परात्पराय च। महेन्द्राय हूंशीलाय। करवीरप्रियाय च।
महत्यनाथक्रमायाथ। नमस्ते कालरूपिणे। विष्टरश्रवसे लोक। द्र
ष्टारत्नाय ते नमः॥ संहारज कल्पवृक्षाय। करुणाय नगाय च। अन
र्घाय वरेण्याय। वृषरूपाय ते नमः॥४०॥ परमेशानिशिषयप्र। ग
र्भाय हरिलाय च। तत्त्वाधिकाय सर्वाय। नमो दीर्घाय गिरिशे॥
नमस्ते पाण्डुरांगाय। ध्यायाय ब्रह्मचारिणे। अनन्तनिष्कला

याथ· सामगाय प्रियाय च। नमो ऽजयाय कृताय· नमस्तत्पुरुषमूर्त
ये॥ कलाधराय रूपाय· पञ्चरूपात्मने नमः॥ ५॥ अनिर्वाच्याय नित्याय·
शिवः पापनाशकराय च। विश्वनाथ्य दुःखकालयागिनेन करूपिरवाप्ति १७
छसाधकरूपाय· नमामहि निरूपिरवे। अगन्याय गुणापाय· स्वधाह
त्सायनो नमः॥ ६॥ जीवहसाय निधये· ज्ञानवन्मधुराय च। उपाधि
नहिताय याथ नमस्ते रूपरूपनाशय॥ नमामूनीन्द्रवार्यैथ· शिवानन्दा

यतो नमः॥ त्रिपुरघ्नाय नमस्तेजो ऽनामये नूतमाय च। चतुर्मूर्ति वपुः स्त्रा
य· नमो वृद्धिद्धियात्मने· उपद्रवहराय च· प्रियसन्दर्शनाय च॥
रूपायरूपाय· वीर[illegible]गाय यतो नमः॥ नैष्कर्म्याय निरूपाय· षड
ङ्गाय विशुद्धाय॥ कूलदाय रूपाय· भुवनेशाय यतो नमः॥ हिरण्यवाह
यजीव· वरदाय नमो नमः॥ १०॥ आदिदेवाय ज्ञाय· बन्धुसंजीव
नाय च। हराय वक्ररूपाय· प्रसन्नाय नमो नमः॥ ज्ञानदरुचिकाय

थ· क्रुद्धाय नमो नमः॥ नमो भाभासुरूपायाथ· शाश्वताय विरूपाक्ष
यज्ञरूपाक्षि सूर्यवंशाय· दक्षयज्ञविघातिने। नमः सर्वात्मने तुभ्यं· विश्व
शिवः पालाय ते नमः॥ विश्वगर्भाय गर्भाय· देवगर्भाय ते नमः॥ संसाराम्बु
वमग्नानां· दुःखसंतापहृतवे॥ मुनिप्रियाय वीराय मूलप्रकृतये न ११
मः॥ समस्ते वं ध्वंसिने ज्ञा· मूलाय ते नमो नमः॥ आत्मस्वरूपकायाथ·
वालुकेन्दुमनाय च। भगवानार्यभायाथ· शान्तदावाग्निरूपाय च।
विचित्रमायिने तुभ्यं· निष्कलं कलिशूलं नमः॥ वह्निमूर्त्तिस्वमहाद

ये· मथनाय नमो नमः॥ नमो हृन्मूर्त्ताय तुभ्यं· निष्कलंकाय ते नमः॥ नमो
हव्याय हव्याय· यज्ञनाथाय ते नमः॥ नमो मध्याय मूर्खाय· वसिष्ठा
य नमो नमः॥ अम्बिकापतये तुभ्यं· महानन्दाय ते नमः॥ सर्वप्रिया
य सत्याय· प्रियनन्दाय ते नमः॥ नित्यानन्दाय वन्दित्रे· मृगहस्ताय ते
नमः॥ ६०॥ अर्द्धनारीश्वरायाथ· कुबेरयुतपालये। वराहयप्रदा
त्रे· बहुरूपाय ते नमः॥ महार्थाय सुसत्याय· कीर्त्तिशीलाय ते नमः।
नमः कलागमायाथ· वेदान्तपारगाय च॥ अष्टमूर्त्तये तुभ्यं मगीवक्र

ऋतिनायच। अघ्राणायनमस्तुभ्यं· गन्धावयहकारिणे॥ पाद
हीनायवाक्षाय· सर्वगगताय नमः। अग्रकायजनमत्राय· नमस्तु
भ्यंविदात्मने॥ नमस्त्रायनमस्तुभ्यं· रसनारहितायच। अमूर्त्ताया
शिवः यमूर्त्ताय· सदसत्यनये नमः॥ जितेन्द्रियायतद्याय· परंधा १८
मिः स्वरूपिणे। नमस्तेसर्वमर्त्यानां· मादिकर्म्मदयालव·॥
सर्गस्थितिविनाशाय· कर्म्मनिर्मुक्तकायच। नमोकर्म्मिनेनम

र्व· दृष्टिरूपाय नमो नमः। वक्रतुमण्डकर्तृणा· पूज्नाभयनमो नमः। वाम
दक्षिणपार्श्वतु लोकनाहुनिर्म्मालिने। नमः सकलकल्याणदा:
यिनेप्रलवायच। स्वरावादान्धीनाय· हूतकालायते नमः॥ विष
याश्चविमग्नानी· समूद्धरणहेतवे। अमृतहस्त्रहस्तपाय· वालिति
कालकवलिने॥ २०॥ यस्तेत्वर्यं यतः सर्व· सर्वंयत नमो नमः। नमो
महाशूलिवायाथ· हास्कवाय नमो नमः। रुक्मिगम्यायरुकानी· सू
क्ष्माय नमो नमः॥ इः ४ धर्बायि इष्टानी· विघ्नयायविवेकिनी ·॥

अलौकिकाय लोकाय· अलोकाय नमो नमः॥ पूर्न चित्र विशेषाय क्रो
धलाय शुद्धाय च। नमः कर्पूरगौराय· सर्पहाराय ते नमः॥ नमः
सिंहासनपानाय· कमनीयाय ते नमः॥ वह्निदर्पविघाताय· वायुदर्प
विघातिने। जगाभिगमाय वीर्याय· वद्याय व्यापिने नमः॥ सूर्यको १९
टिप्रकाशाय· निःक्रियाय नमो नमः॥ चन्द्रकोटिसुशीलाय· कूलिना
य नमो नमः॥ नमः स्वरूपरूपाय· निश्चलाय नमो नमः॥ नमस्त्रय
प्रतिष्ठाय· नमः श्रीसुसमाधये। जकरूपाय रूपाय· विश्वनाडिङ

नाय च। सर्व्वोत्तमाय कौलाय· प्राणाय हृदयं नमः॥ नमः पवाय
ज्ञायाय· चिन्मात्राय नमो नमः॥ ध्यानागम्याय ध्येयाय· ध्यानरू
पायते नमः॥ नमःस्कं भाग्यवते त्वर्थ· विरूपाय नमो नमः॥ प्रतिष्ठा
ये धर्म्मगोप्त्रे निधनाय प्रजाय च॥ २००॥ योगिगम्याय योगाय
योगगम्याय ते नमः॥ नमः श्रीलीलेश्वराय अथ· सर्वज्ञकीर्तिधनाय च।
धर्म्मध्वजा[illegible]य धन्याय· वृषकाय नमो नमः॥ महेन्द्राद्यैश्चचन्द्रा
र्कै नमिताय नमो नमः॥ महर्षिवन्दिताय अथ· प्रकाशाय स्वधर्म्मि

ण॥ नमो हिरन्यगर्भाय · नमो हिरन्यपाय च॥ जगद्बीजाय हातायः
स्थाय च कृतव नमः॥ आधिपत्याय कामाय · स्थायाय चमीस नमः॥ नम
ः सर्व्व नमस्तु भ्रू · सयाय सकनाय च · । नमस्तु ऋक्षवर्णाय · नमस्कृ
शि ३: क्षयानय ॥ १०७ ॥ आगमलमनविकिताय · दिव्यनृत्याय ते नमः॥ जग २०
तामकनाधय · मायावीजाय ते नमः॥ सर्व्वहर्म निविष्टाय · ब्रह्म
वकृतमाय च · । ब्रह्मानन्दाय रुवते · ब्रह्मान्धायने मा नमः॥ ऋमि
सावार्लिसंकर्त्रे रुवसावथय नमः॥ हिरन्यगर्ठपूत्रानां · ब्रानसं

वक्षणाय च॥ दूर्व्वासस्य वश्विकाय · चाहिताय नमो नमः॥ नमो ऽर्द्धका
काय · षड्भुर्मि वहिताय च॥ प्रकृतिरुवनाशाय · तामसाय पचमष्ठि
न · । ऊनकेकोटिब्रह्माण्डनायकाय नमो नमः॥ ११० ॥ एकाकि
ने निर्म्मलाय · द्रविणाय दमाय च · । नमस्त्रिलोचनायाथ · निपिवि
ष्टाय वन्धवे · ॥ त्रिविष्टपश्वरायाथ · नमो व्याघ्रेश्वराय च · । विश्वे
श्वराय दातृते · नमः श्वत्रेश्वराय च ॥ वासेश्वराय यूधिने · कन्दु
केशाय ते नमः॥ नमो योगीश्वरायाथ · दिवोदासेश्वराय च ॥ नो
गेश्वराय न्यायाय · न्यायनिर्वाहकाय च · । नन्दाय च हूपाताय

कालचक्रप्रवर्त्तिने ॥ विचक्षणाय दक्षाय ध्वनाध्याय नमो नमः ॥
नीलजीमूतदेहाय · पनामश्चाशिवनमः ॥ २२ ॥ शवनागगापाल्रा
य · महादेवपतये च · सर्वपापहरनायाथ · महानादाय ते नमः ॥
शिवः कष्टच्छेदजयदात्रे · विल्वकेशाय ते नमः ॥ दिव्यरागाय दक्षाय · २१
कालविदाय नमो नमः ॥ कामपालयित्रे विश्वाय · वि~~श्वाय यज्ञाय च~~ ।
~~मधुप्रजनितापाय · नमः सर्वध्वनाय चा~~ ॥ २१ ॥ ~~स्व~~विश्राय नमो
नमः ॥ नमो मामाता महायाथ · नमस्ते मानविश्वने ॥ निःसंगो हेयस्तुन्ता

वामाय यज्ञाय · वदनि ॥ ध्वस्थिताय च आत्मसंगमाय मूर्वीनाय · नागरू
जाय ते नमः ॥ व्याघ्राय वार्हरूपहरूकाय · स्कन्दाय दक्षिणे नमः ॥
॥ २४ ॥ वांछितफलाय च हरस्याय · सुखकाय च वनियसे · गरुनाय विनामा
य · त्रिस्थानकाय नमो नमः ॥ महीधनाय महात्मने · वटवृक्षाय ते नमः
॥ ज्ञानदीपाय दुर्ग्राय · सिद्धीनामभिनाय च · श्रीमन्मुक्तिवीजा
य · कुमलाय विलासिने · प्रचकाय विलोकाय · हविर्द्धनाय ते न

मः॥ गौरीवाय महात्याय। हाजनाय सूराणिने। महायज्ञाय गीक्ष्नाय
नमस्ते स्तनवाविने॥ नमः प्रतिहिन्नायाथ। महात्माहाय ते नमः॥
पद्मनाभाय लिसव। प्रांशवे च कपालिने॥ १४७॥ सहजाय गहस्का २४
निवः य। सन्ध्यानाथाय जिष्णवे। च क्लिसं प जितायाथ। विदलाह वपा
लिने॥ संग्रामाय ननमाय। गुविहाह्याय ते नमः॥ त्रिपुरायाय सू
मैं न। [illegible] नाय च धूर्वाय च॥ मनुष्य वाक्ष्य [illegible] काम क्लाय निरवलि
ॐ कामपालाय योगाय कामेश्वराय किरिटिने। अमोघविक्रमायाथ। नग्नाय दलघी

[illegible]
नः। निर्लयाय जटाधारये महाकालाय ते नमः॥ नमो विरूपरूपा
य। नकिगम्याय ते नमः॥ नमः सर्वमयि सदस। त्यनायहूत्रनाय
च॥ १७०॥ नमः। धर्मपालाय। धनाध्यक्षाय सिद्धये। महारू
पाय कल्याय। कल्याणाय लोगिने॥ सर्वलोगसमृद्धाय। सर्वे
वनाय नमो नमः॥ नमस्ते स्वप्रकाशाय। स्वच्छन्दाय स्वतन्त्रवे॥ स
र्वज्ञ मर्त्याय गुर्वे। हिन्वण्य नमः नमः॥ भावदाय हूनीलाय। कौ
ॐ नमो भक्तिप्रियायाथ श्वेतरक्षापराय च॥ सुकुमार महापापहराय रथिने नमः॥ १८४
पक्षाय नमस्ते ओंमगाय च॥ चिन्मयाय नमः। [illegible] ज्योतिषे क्षेत्रगाय च। अदीनाय दीनीया

निव:

लिकायधनायच॥ॐ ह्रिं वामायगत्वाय· थ्वालकल्वायतेनमः।
ॐ विश्वमथनायाथ· सुप्रतीकाय नमानमः॥ ॐ वावतुम्ह
गर्भाय· चतुर्मुखायतये नमः॥ नमःकालाग्निरुद्राय· श्मशानाय
सुजनायच॥ ॐ ह्रिं ह्रूं ध्रुवाय ईश्वराय शुक्लगायसूर्याकर्ण· नमः
समयनाथाय· सामवायगुह्यायच· निर्मलाय नमस्तुत्यं स्तु
न्दः साचायदक्षिण·श्मशानलिंगायमित्रायजगन्मूर्तिकावि २६

[redacted] लिने॥ १६०॥ नमःकारुण्यनिधये· [redacted] लोकायजयशालि
ने· ज्ञानादाचायवीजाय· जनविश्रामहेतवे॥ ॐ ध्रुवधूमायलि
ङ्गाय· स्कन्दसीवरुवे नमः॥ नमः श्रीमन्त्रायगुह्याय· सर्ववन्ध
विमाचने॥ उदारकीलयगर्भे· स्वमन्त्रवदनायच· विसमवव
दकाचाय· नमोज्ञानजिष्णुजिष्णवे॥ चक्रिणेदवदवाय· गदा
हस्तायपुत्रिणे· नमसेयाविजानाय· [redacted] गन्धाविपनाय
नमः॥ सर्वनासवाधिपनाय· प्रजनगायतेनमः॥ नमःप्रमा

दक्षाय सूत्रधार्यै गणनायकाय च ॥ १६७ ॥ जगन्नीवाय नुक्राय · सर्वा
न्तर्यामिने नमः ॥ हर्कीनाय सूक्ष्माय · कृताय पूज्यमालिने
॥ मूर्त्तये · ध्यायमनन्ताय · वीजस्थाय सञ्जीवाय · ॥ वामदेवाय जनका
नव: याथ · नमस्कपालिवामसे ॥ ग्रामकर्णाय यात्याय · धर्म्मपीठ २८
याते नमः ॥ महावीर्याय दीकाय · वृद्धाय गनयनमः ॥ जिह्व
स्थाय मघवते · कनककवचाय च · ॥ कालचाय रुगवाते · वालद

म मा
र्विदृताय च ॥ ऊर्ध्वलिङ्गियाय च गम्याय · जनानन्दकनाय च · ॥ सर्वज्ञा
वाय · क्षोम्याय · चिन्त्याय चन्द्रमौलिने ॥ १७० ॥ नमस्ते जोतुक
र्माय · सूर्याध्यक्षाय नेनमः ॥ श्वान्तिषकुण्डलीनाय · चक्रदा
याव वाय च ॥ वसकाय सूत्रहराय · जयाधिमथनाय च · ॥ प्रपूर्व
जन्माय याय · दृषदक्षाय नेनमः ॥ भावविश्ववसूत्र जिते · ध्वनयी
नाय नेनमः ॥ नमस्ते वज्रवेषिकाय · नमिश्रमथनाय च · ॥ भ्रमा
थिने निदाधाय · चित्रमार्गाय नेनमः ॥ त्रिकालयायसत्याय ·

तीर्थदवाय ते नमः॥ नित्यवश्याय ●दानाय विचित्रगुणकाय नमः॥
नमाल्पलाय नमस्ते · विमानताय स नमः॥ १०३॥ अद्विकान्तस्वरूपा
य · मघाधिपतये नमः॥ विक्रमाय स्वतन्त्राय · स्वतन्त्रगताय नमः॥
अपापाय नत्व विदं · कोय दीनाय ते नमः॥ पञ्चअम्याय वदान्याय · २७
विष्णुप्राणरूपाय चे॥ अगोचराय मकाय अंसाय वज्रवाणये ·
न्याय पद्महस्ताय · नमस्ते कमदग्रये॥ अनावलोय मूकाय · मा
तृकापताय नमः॥ नमस्ते वीजकाशाय · तीव्रानन्दाय मूकाय॥ न

मस्ते विम्बदेवाय · गान्धाराय ते नमः॥ विलाचनाय गीयाय · हेम
महेशाय ते नमः॥ १८०॥ अनाथन्काय चन्द्राय मनानाथाय ते नमः॥
ज्ञानस्कान्धाय रुद्राय क्रविलाय महर्षये॥ नमस्ते कालाग्निका
लाय · दर्वासिंहाय ते नमः॥ नमस्ते मणिरूपाय · चतुर्वेदाय ते न
मः॥ खराव्याय हृत्वासाय · हर्षपादाय ते नमः॥ नमस्ते लिवध
र्म्माय · महाधर्म्माय ते नमः॥ ७ सन्नाय नमस्तुर्ये · सर्वात्मस्थिता ति

य नमः॥ स्वयम्भुवे कलन्नाय कृ नाकृत महात्मने॥ १८४॥ ॥ श्रीम
हानिकउवाच॥ जपकृम तानन्द वा नाम्नां दशमती सिमाभू॥ मम
वानित्रियकनीं महामाल्किप्रदायिनीभू॥ सर्जमकमदात्रीकु म २८
र्व्वसिद्धिमयी गुरुतामू॥ य४प८० कृतू या वा वि सर्व्वपापै ४ प्रमुच्य
ते॥ पुत्रकामी लभ त्पुत्रं चार्थ कामस्तुवार्थ तामू॥ प्राप्नुयात्स्व
र्गयारु क्षा धनधान्यादिकं बहून्॥ शिवालय न दीतीरे ९४ वृक्षे

मूले वि जेवनः प्रजप ल्मुद्धि दं द वा ४ गु वोद ८ त्ता [illegible] मीनचो॥
धनकामन रुकूया त्यता केवि [illegible] पत्र के ४ माकृ कामन नगर्थन
घ तानप्रति नामन ४॥ पुत्रकामन रुकूया त्रिलाक्ष न यथान्यसा श्री
यु ४ कामन रुकूया दीर्घ नमयूना तथा॥ २०॥ मत्समीप व्रदा
यव स्य स्वारु क्षा उपद यथा जीव त्स्वरूप तां प्राप्य सायुज्यं सम
वाप्नुया ७॥ कालो पि जन मा क्ताादि मम रुक्षेन लूं वति॥ श्रु हेला
मीकूनाकस्य नेष्या मिगन कलमें॥ त्रिसन्ध्या मूजपद रुक्षा व
र्ष

सर्वं नित्यमाश्रितः। मत्विक्षा मन्मनाहत्वा सर्वत्रागेः प्रमूच्यते॥ बुद्ध
बोधिं न मन्यूर्ध्वं यत्यूर्ध्वं वदपाठतः॥ न सर्वत्राप्यनपूर्वि यकाग्र
मनसा मना॥ कन्याकादिप्रदानस्य यत्फलं लभते नरः॥ तत्फलं २९
श्रीबुः लभते समस्य श्राम्रीदमगाती जपात्॥ १९९॥ अश्वमेधसहस्रस्य
यत्फलं लभते नरः। कपिलागोप्रदानस्य तत्फलं बोधनात् रुचं७॥
यः श्रेष्ठो ज्ञातिमहां महाविद्यो अवयवधापिरुकिनः सापिमूकिम

वाश्राति यत्र गत्वा न शोचति॥ यत्र नाम सर्वदा ल ग्रहकृष्णान्धुके
रवाः॥ बोधनादस्य नश्यन्ति जीवं चतुर्नन्दमंतीर्॥ ब्रह्महत्यादिपापा
नां नाशः स्यात्कुर्वनेन च। किं पुनः बोधनादस्य मुक्तिः स्यादन
पायिनी॥ श्रीलोकनाथ महादेवं गणवान् पत्रमेवयः। पुनरया
द रुगवान् कथं पद्यावनयापुनः॥ २००॥ दीयतामात्मरुकौ धा यद्
कारुव धातेकं। श्रीलोकनाथं देवपत्रमानन्दरूपवान्॥ २०१॥
श्रीकृष्णउवाच॥ तदेवपूचानामा लब्धवान्धर्मसर्वलोकवान्॥ श्रु

अनन्धकदनुकारखानु· प्रजन्मापचपूद्दह ॥ निर्लंत्रिषवपाप्नापी·
त्रिसं ध्यामहूत्मचनूजिवमू ॥ तदासोदवदवाचि· प्रचेत्रु ४ प्राहनाघव
निव: मू ॥ ॐ दपाहुतदिर्यं· प्रुगहापाचपूद्दहा ॥ तदासाध्योपलक्षीज ३०
द्दिमात्मोकमर्हस्मि ॥ तदाप्रहतिलादवा ४ प्रजपामिमहुरुकित ४ ॥
लक्रानुपचयारुह्ला· रुवन्के ४ सर्वत्रवद्दि ॥ २०८ ॥ ॥ जीवदया
सडवाच ॥ ततस्कुसवयत्मवं· जगहुर्म्मूनिपूंगवा ४ ॥ तद्द ४ क